M. T. B. COLLEGE, SURAT
Manuscripts Library

No. Ref. / Sur. 694
44

Title: Navratra Puja Vidhi

694

नवरात्र पूजा विधि:

Navaratra Pūjā Vidhi : Title

: Author

: Editor

: Year, Vols.

: Publisher

694 : Remarks

नवरात्रपूजाविधिःप्रारंभोयम् ॥श्री

नवरा॰ पू॰ १

श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥
आचम्य प्राणानायम्य देशकालौ संकी
र्त्य श्रीपरमेश्वरप्रीत्यर्थं अस्माकं संकु
टुंबानां सहपरिवाराणां द्विपदचतुष्प
दसहितानां क्षेमस्थैर्य आयुरारोग्य
ऐश्वर्याभिवृध्यर्थं समस्तमंगलावा
प्त्यर्थं समस्ताभ्युदयार्थं ममसपरिवा
रस्य लक्ष्मीप्रीतिद्वारा सर्वापच्छांतिपूर्वकं
दीर्घायुर्विपुलधनधान्यपुत्रपौत्राद्यभि ३

वृद्धिस्थिरलक्ष्मीशत्रुपराजयसदाभीष्ट
सिध्यर्थं श्रीविजयादुर्गाबिंदु[illegible]धवमहा
विष्णुप्रमुखपंचायतनदेवताप्रीत्यर्थं
शारदीनवरात्रमहोत्सवपर्वनिमित्तं
अद्यप्रतिपदिनमारभ्यमहादशमी
दिनपर्यंतं दीपस्थापनपूर्वकं देवतास्था
पनं करिष्ये ॥ आसनादिन्यासं कृत्वा
कलशपूजनं शंखघंटापूजनं च कृत्वा गण

न-पू

२ पतिपूजां कुर्यात्॥ आसने अक्षतादिना
पूरयित्वा॥ अष्टदलं विलिख्य॥ अ[illegible]
पूर्वोच्चरित इत्यादि श्रीविजयादुर्गा विंदु
माधव महाविष्णुप्रमुखपंचायतन देवता
प्रीत्यर्थं प्रतिपद्दिनमारभ्य महादशमी
दिनपर्यंतं दीपस्थापनं करिष्ये॥ दीप
प्रक्षालनं कृत्वा दीपं पंचोपचारैः पूज
येत्॥ तदसुभि० सुप्रतिष्ठितमस्तु
ततः आग्नेयादि चतुष्कोणेषु॥ गणपत २

येनमः॥ गणपतिमावाहयामि॥ एवं सर्वत्र॥
दुर्गायै नमः दुर्गामा०॥ क्षेत्रपालाय० क्षेत्रपा
लमा०॥ वास्तोष्पतये० वास्तोष्पतिमा०॥
इंद्राद्यष्टौ लोकपालानावाह्य॥ मध्ये॥
जातवेदसे मारीचः कश्यपो दुर्गा त्रिष्टुप्॥
श्रीविजयादुर्गावाहने विनियोगः॥ ॐ
जातवेदसे सु० श्रीविजयादुर्गां सांगां
सपरिवारां सायुधां सशक्तिकामावाह
यामि॥ इदं विष्णुः काण्वो मेधातिथि
र्विष्णुर्गायत्री॥ विंदुमाधवावाहने वि०

न॰पू

३ ॐ इदं विष्णुर्वि॰ श्रीबिंदुमाधवं सांगं सपरि
वारं सायुधं सशक्तिकं आवाहयामि॥ ॐ
तदस्तु॥ सुप्रतिष्ठितमस्तु॥ देशकालौ सं
कीर्त्य श्रीविजयादुर्गाबिंदुमाधव महावि॰
प्रीत्यर्थं शारदीनवरात्रमहोत्सवे प्रति
पद्दिनमारभ्य महादशमीदिनपर्यंतं ब्रा
ह्मणद्वारा श्रीसूक्तस्य शतावृत्ति जपाख्यं
कर्म करिष्ये॥ अथ नित्यपूजाविधिः
आचम्य प्राणानायम्य देशकालौ संकीर्त्य ३

श्रीपरमेश्वरप्रीत्यर्थं मम सकुटुंबस्य सपरिवा
रस्य लक्ष्मीप्रीतिद्वारा सर्वापच्छांतिपूर्वकं दी
र्घायुर्विपुलधनधान्यपुत्रपौत्राद्यभिवृद्धि
स्थिरलक्ष्मीकीर्तिलाभशत्रुपराजयसदा
भीष्टसिद्ध्यर्थं शारदीनवरात्रमहोत्सवे
अद्यप्रतिपद्यां माध्यान्हकाले महापूजांध्या
नाऽवाहनादि पूर्वसूक्तेन श्रीसूक्तेन श्री
सूक्तेन पौराणोक्तमंत्रेण मूलमंत्रेण च षो
डशोपचारैः पूजां करिष्ये॥ आसनादिक

न·पू·
४

लशपूजनं शंखपूजनं घंटापूजनं चकरिष्ये
शरीरशुध्यर्थं पुरुषसूक्तश्रीसूक्तन्यासां
श्चकरिष्ये ॥ तथा मूलमंत्रेण षडंगन्यासं
करिष्ये ॥ पृथ्वीतिमंत्रस्येति आसनविधिं
कुर्यात् ॥ पुरुषसूक्तन्यासं कृत्वा ॥ श्रीसू
क्तन्यासं कुर्यात् ॥ तद्यथा ॥ हिरण्यवर्णा
मितिपंचदशर्चस्य सूक्तस्य आनंद
कर्दमःश्चिक्लीतेंदिरासुता ऋषयः श्री
र्देवता आद्यास्त्रयोनुष्टुभः ॥ चतुर्थीबृ ४

हती पंचमीषष्ठी त्रिष्टुभौ ॥ सप्तम्याद्यष्टावनुष्टुभः
अंत्योपरिष्टाद्बृहती ॥ ताम्म आवह इति प्रस्तार
पंक्तिः ॥ श्रीप्रीत्यर्थे न्यासे विनियोगः ॥ ॐ हिर
ण्यवर्णां० ॥ शिरसि ॥ तांम आव० नेत्रयोः ॥ अ
श्वपूर्वां० कर्णयोः ॥ कांसोस्मितां० नासिका० ॥
चंद्रांप्रभा० मुखे ॥ आदित्य० कंठे ॥ उपैतुमां०
बाह्वोः ॥ क्षुत्पिपासा० हृदये ॥ गंधद्वारां० नाभौ०
मनसः० कट्यां ॥ कर्दमेन० गुह्ये ॥ आपस्रजं०
ऊर्वोः ॥ आर्द्रांयः क० जान्वोः ॥ आर्द्रांपुष्क० जं
घयोः ॥ तांम आव० पादयोः ॥ यः शुचिः प्र० स

न॰पृ॰ ५

वंगि॥ नमो देव्यै महादेव्यै इति मंत्रेण षडंगन्यासं
कुर्यात्॥ अथ देविन्यासः॥॥ श्रियै नमः शिरसि॥
वरदायै॰ मुखे॥ विष्णुपत्न्यै॰ नेत्रयोः॥ भाग्य
दायै॰ नासिके॥ सुवर्णमालिन्यै॰ कंठे॥ रजत
स्रजायै॰ उपकंठे॥ स्वर्णग्रहायै॰ दक्षिण बाह्वोः
सुवर्णप्रकारायै॰ वामबाह्वोः॥ पद्मवासिन्यै॰
स्तनयोः॥ पद्महस्ते॰ दक्षिणहस्ते॥ पद्मप्रिया
यै॰ वामहस्ते॥ मुक्तालंकारायै॰ हृदये॥ सूर्या
यै॰ उदरे॥ चंद्रायै॰ नाभौ॥॥ बिल्वप्रियायै॰ द
क्षिणकरे॥ ऐश्वर्यै॰ वामकरे॥ भुक्त्यै॰ द॰कु ५

क्षौ॥ मुक्त्यै॰ वामकुक्षौ॥ विभूत्यै॰ दक्षिणकट्यां
ऋध्यै॰ वामक॰॥ समृध्यै॰ गुह्ये॥ पुष्ट्यै॰ दक्षि
णउरौ॥ तुष्ट्यै॰ वाम उरौ॥ धनदायै॰ दक्षि॰जा
नुं॥ श्रध्धायै॰ वामजानुं॥ धात्र्यै॰ दक्षि॰पादे
विधात्र्यै॰ वामपा॰ महालक्ष्म्यै॰ सर्वांगे॥ क
लशस्येति कलशपूजनं॥ शंखादौ चंद्र इति
शंखपूजनं॥ आगमार्थंतु इति घंटापूजनं
अपवित्रः पवि॰॥ आत्मानं पूजाद्रव्याणि
चप्रोक्षय॥ येभ्यो माताम॰॥ अथध्यानं॥ ध्ये
तांग॰॥१॥ ध्येयः सदा॰२॥ ध्यायेन्नित्यं॰३॥

न॰पू॰

६ शांताकारं॰॥४॥ नीलाभ्राभांकराक्षैरलिकु
ऽभयदामौलिबध्येंदुलेखांशंखचक्रेकृ
पाणांत्रिशिखमपिकरैरुद्वहंतींत्रिनेत्रां॥
सिंहस्कंधाधिरूढांत्रिभुवनमखिलंतेजसे
वितांपूरयंतींध्यायेदुर्गांजयाख्यांत्रिनय
नऽसितांसेवितांसिद्धिकामैः॥५॥ नमो
देव्यैमहादे॰ श्रीविजयादुर्गाविंदुमाधवम
हाविष्णुप्रमुखपंचायतनदेवताभ्यो नमः॥
ध्यायामि॥ ॐ सहस्रशीर्षा॰ ॐ हिरण्यवर्णां॰
नानारत्नप्रदांदेवींसमाराधयेच्छुभं॥पी ६

तांबरधरांनित्यंशोभनांक्षोभवर्जितां॥ नमोदेव्यै॰
श्रीविजया॰ आवाहयामि॥ ॐ पुरुष ए॰ तांमआ
वह॰ चतुर्भुजांत्रिनेत्रांचवरदाभयपाणिनां॥
सिंहारूढांमहादेवींसर्वैश्वर्यफलप्रदां॥ न
मोदे॰ श्रीविज॰ आसनं॥ ॐ एतावानस्य॰
अश्वपूर्वां॰ तप्तकांचनसंकाशांकमलांके
मलाऽयां॥ रत्नसिंहासनस्थांचवंदितां
परमेश्वरीं॥ नमोदे॰ श्रीविज॰ पाद्यं॥ ॐ त्रि
पादूर्ध्व॰ कांसोस्मितां॰ जगद्वंद्यांमहाल
क्ष्मींप्रकृतींविष्णुवल्लभां॥ अनर्घ्यगुण

संयुक्तां नमामि त्वां सुरेश्वरीं ॥ नमो दे॰ श्री
विज॰ अर्घ्यं ॥ ॐ तस्माद्विराळ॰ चंद्रां प्रभा॰
विद्याधरीं महादेवीं पद्माक्षीं लोकमातरं
सर्वैश्वर्यप्रदां देवीं भाचम्ये स्त्वां प्रपूजयेत्
नमो दे॰ श्री विज॰ आचमनीयं ॥ ॐ यत्पु
रुषेण॰ आदित्यव॰ ॐ कनिक्रदज्जनुषं॰
अभ्यंग स्नानं स॰ स्नानानंतरं उष्णोदक स्ना॰
ॐ आप्यायस्व स॰ ॐ दधिक्रावणो॰ ॐ घृतं
मिमिक्षे॰ ॐ मधुवाता॰ ॐ स्वादुपवस्वदि॰ ८

पंचामृतस्नानं स॰ ॥ पंचोपचारैः पूजयेत् ॥ ॐ
आपो हिष्ठाम॰ श्री विज॰ शुद्धोदक स्नानं स॰ ॥
ॐ गंधद्वारां दुरा॰ षष्ठेन गंधोदक स्नानं स॰ ॥
पुरुषसूक्तेन श्री सूक्तेन च अभिषेकं कुर्यात् ॥
नमो देव्यै॰ श्री वि जया॰ अभ्यंगाभिषेक स्ना
नं स॰ ॥ ॐ तयज्ञं॰ उपैतुमां॰ यस्य ब्रह्मा द
यो देवाः प्रभवंयत्कुमा दरात् ॥ आ समर्था
स्तु ते सर्वे सात्वं पाहि हरिप्रियं ॥ नमो दे॰ श्री
विज॰ वस्त्रं ॥ ॐ तस्माद्यज्ञात्सर्वहुतः सं॰

१·पू·

श्रुतिपा॰ पीततंतुसमं मिश्रं रक्तकौशेयवासं॥ मुंचन्मुक्तावलीयुक्ता कंचुकीप्रतिगृह्यतां॥ नमो दे॰ श्रीविज॰ यं ज्ञोपवीतं॥ कंचुकीं च स॰॥ ॐ तस्माद्यज्ञात्सर्वहुतऋ॰ गंधद्वारां॰॥ श्रीखंडं चंदनं॰ नमो दे॰ श्रीविजया॰॥ विलेपनार्थे चंदनं॥ हरिद्रां॰॥ श्रीविज॰ हरिद्रां॰॥ कुंकुमं॰ श्रीविज॰ कुंकुमं॰॥ कज्जलं नेत्ररोग॰ श्रीविज॰ कज्जलं स॰॥ कंठसूत्रं ताडपत्रं हरिद्रा कुंकुमांजनं॥ सिंदुरादिप्रदास्यामि सौभाग्यं देहि मे व्ययं

श्रीविज॰ सकलसौभाग्यद्रव्यं स॰॥ गजदंतस्य वर्णेण फणिका निचनिर्मिता:॥ केशसंवाहनार्थाय देवि त्वं प्रतिगृह्यतां॥ श्रीविज॰ फणिकां स॰ अक्षताश्च सु॰॥ श्रीविज॰ अलंकारार्थे अक्षतां स॰॥ ॐ तस्मा द्दश्वा अ॰ मन स:कों॰ माल्यादीनि सु॰ नमो दे॰ श्रीविजया॰ यथाकालोद्भवपुष्पाणि स॰॥ ॐ अहिरिव भोगै॰॥ युवा सुवासा॰॥ नाना परिमल द्रव्यं कस्तूरी कर्पुरान्वितं॥ पुष्पद्रव समायुक्तं गृहाण जगदंबिके॥ श्रीविज॰॥ नाना परिमल द्रव्यं स॰॥ अमृतोद्भव

न॰पू॰
१

श्रीवृक्ष महादेवप्रियं सदा॥ बिल्वपत्रं प्रयच्छा
मि पवित्रं तं तं सुरेश्वरि॥ श्रीविज॰ बिल्वपत्रं
स॰॥ उग्ररूपिं चोग्ररूपामुग्रतेजां महासुरीं
पूजां करोमि चार्वांगी पल्लवैर्नंदनोद्भवैः॥
श्रीविज॰ पल्लवं स॰॥ मंत्राक्षरमपेलक्ष्मीः
साक्षतान् गंधसंयुतान्॥ दूर्वांकुरान्त्रयच्छा
मि देहि मे चिपुजां श्रियं॥ श्रीविज॰ दूर्वांकु
रान्स॰॥ शरत्काले समुत्पन्नान्याहृतानि
मया शुभे॥ फलानीमानि वरदे गृण्हीष्व
सुरसत्तम॥ श्रीविज॰ फलं स॰॥ अथांगपूजा

ॐ दुर्गायै॰ पादौ पूजयामि॥ कात्यायिन्यै॰ गु
ल्फौ पू॰॥ सावित्र्यै॰ जानुं पू॰॥ सरस्वत्यै॰ ऊ
रू पू॰॥ भद्रकाल्यै॰ कटिं पू॰॥ मंगलायै॰ ना
भिं पू॰॥ शिवायै॰ उदरं पू॰॥ आत्मयोन्यै॰ हृ
दयं पू॰॥ स्वधायै॰ कंठं पू॰॥ महिम्ने॰ मुखं पू॰
नारायण्यै॰ नासिकं पू॰॥ रौद्रमुख्यै॰ श्रोत्र
पू॰॥ सिद्धवाहिन्यै॰ नेत्रे पू॰॥ महादेव्यै॰ ल
लाटं पू॰॥ कुमार्यै॰ शिरः पू॰॥ महालक्ष्म्यै॰ स
र्वांगं पू॰॥ अथ आवरणपूजा॥ नंदायै॰॥

न-पू०

१० रक्तदंतिकायै० शाकंभर्यै० भीमायै० भ्रामर्यै० शिव
दूत्यै० श्रीविजयादुर्गाबिंदुमाधवमहाविष्णुप्रमुख
पंचायतनदेवताभ्यो नमः सकलपूजार्थे गंधाक्ष
तपुष्पं समर्पयामि॥ दयाब्धे त्राहि संसारसर्पान्मां
शरणागतं॥ भक्त्या समर्पये त्वाहं प्रथमावरणार्चनं
अनेन प्रथमावरणार्चनेन श्रीविजयादुर्गाबिंदुमा
धवमु० देवताः प्रीयंतां॥ एवं सर्वत्र॥ ॐ ब्राह्म्यै० मा
हेश्वर्यै० कौमार्यै० वैष्णव्यै० वाराह्यै० इंद्राण्यै० चा
मुंडायै० महालक्ष्म्यै० श्रीविजयादु० सकलपू० दया
ब्धे० द्वितीयाव० प्रीयंतां॥२॥ ॐ इंद्राय० अग्नये०
यमाय० निर्ऋतये० वरुणाय० वायवे० सोमाय० १०

ईशानाय० ब्रह्मणे० विष्णवे० श्रीविजयादु० सकल०
दयाब्धे० तृतीयाव० प्रीयंतां॥३॥ ॐ असितांगभैर
वाय० रुरुभैरवाय० चंडभैरवाय० क्रोधभैरवाय० उ
न्मत्तभैरवाय० कपालभैरवाय० भीषणभैरवाय०
संहारभैरवाय० श्रीविजयादु० सकलपू० दयाब्धे०
चतुर्थाव० प्रीयंतां॥४॥ मालिन्यै० कमलायै० वारि
ण्यै० यशसनायै० कुलिशायै० गदायै० वज्रा
यै० त्रिशूलायै० परशवे० शंखायै० घंटायै० पाशा
यै० शक्त्यै० चंडायै० चर्मणे० पानपात्रायै० कमं
डलुअपदेवताभ्यो० श्रीविजयादु० सकलपू० दयाब्धे०
पंचमाव० प्रीयंतां॥५॥ ॐ रविमंडलाय० सोमम
डलाय० वह्निमंडलाय० श्रीविजयादु० सकलपू०

दयाब्धे॰ षष्ठाव॰ प्रीयंतां॥६॥ धूम्रार्चिषे॰ उष्मज्वा
लिन्ये॰ विस्फुलिंग्ये॰ स्क॰श्रिये॰ सुरूपाये॰ कपिला
ये॰ हव्यवाहनाये॰ शेष्ट्रे॰ संव्हारिण्ये॰ श्रीविजयादु॰
सकलपू॰ दयाब्धे॰ सप्तमावर॰ प्रीयंतां॥७॥ तपि
न्ये॰ तापिन्ये॰ धूम्राये॰ मरीच्ये॰ ज्वालिन्ये॰ रुच्ये॰
सुषुम्नाये॰ भोगदाये॰ विश्वाये॰ बोधिन्ये॰ धारि
ण्ये॰ क्षमाये॰ श्रीविजयादु॰ सकलपू॰ दयाब्धे॰ अ
ष्टमाव॰ प्रीयंतां॥८॥ॐ अमृताये॰ मानदाये॰ पू
षाये॰ पुष्ट्ये॰ तुष्ट्ये॰ रत्ये॰ धृत्ये॰ शशिन्ये॰ चंद्रिको
काये॰ क्रांत्ये॰ ज्योत्स्न्ये॰ श्रिये॰ प्रीत्ये॰ पूर्णाये॰ का
मदाये॰ श्रीविजयादु॰ सकलपू॰ दयाब्धे॰ नवमाव॰

प्रीयंतां॥९॥ खड्गधारिण्ये॰ वज्रहस्ताये॰ दैत्यदा
नवनाशिन्यै॰ महाकाल्यै॰ माहालक्ष्म्यै॰ माहासर
स्वत्यै॰ श्रीविजयादु॰ सकलपू॰ दयाब्धे॰ दशमाव॰
प्रीयंतां॥१०॥ अथ देवी अष्टशत नामावली॥ॐ
कारः सर्वत्र॥ॐ आदिशक्त्यै॰ महादेव्यै॰ अंबिका
ये॰ परमेश्वर्यै॰ जयाये॰ विजयाये॰ मोहरूपाये॰
माहामाये॰ माहेश्वर्यै॰ लोकरक्षाये॰ दुर्गाये॰ भ
क्तचिंतामण्ये॰ मतये॰ सिध्यलक्ष्म्यै॰ महालक्ष्म्यै॰ स
र्वसिध्धिप्रदायिन्यै॰ मंत्रमूर्त्यै॰ महाकाल्यै॰ सर्व
मूर्तिस्वरूपिण्ये॰ वेदमर्तये॰ वेदवेदाये॰ वेदांग्ये॰
व्यवहारिण्ये॰ नारसिंह्यै॰ भगवत्यै॰ रुद्राये॰ रुद्र

१२ रूपिण्यै॰ नारायण्यै॰ नागयज्ञोपवीतिन्यै॰ विष्णुपत्न्यै॰
शंखचक्रगदाधारिण्यै॰ जटामुकुटशोभिन्यै॰ चतुर्भु
जायै॰ कोमलांग्यै॰ विष्णुप्रदायै॰ त्रैलोक्यव्यापिन्यै॰
वेदपूज्यायै॰ त्रैलोक्यपूजितायै॰ रक्तदंतिकायै॰ कौ
मार्यै॰ बालायै॰ परमकल्याण्यै॰ महिषासुरमर्दिन्यै॰
पद्मिन्यै॰ वागीश्वर्यै॰ विघ्ननाशिन्यै॰ पार्वत्यै॰ शुंभा
सुरमर्दिन्यै॰ ललितायै॰ विशालमूर्तये॰ चामुंडायै॰
मेघज्योत्स्नायै॰ आत्मज्योतिषे॰ परमज्योतिषे॰ सूर्य
चक्षुषे॰ सर्वज्योतिस्वरूपिण्यै॰ सहस्रमूर्त्यै॰ दैत्यदा
नवनाशिन्यै॰ आयुर्लक्ष्म्यै॰ धनुर्लक्ष्म्यै॰ विचलक्ष्म्यै॰
विघ्ननाशिन्यै॰ अनंतरूपिण्यै॰ चंद्रायै॰ चंद्रचूडा
यै॰ वरदायै॰ सर्वप्रकाशायै॰ वसुप्रदायै॰ स्वर्णमा १२

लिन्यै॰ रजतस्रजायै॰ स्वर्णप्रकाशायै॰ सूर्यायै॰ चंद्रा
यै॰ बिल्वप्रियायै॰ ऐश्वर्यायै॰ भूत्यै॰ विभूत्यै॰ ऋद्ध्यै॰
समृध्यै॰ सर्वसमृध्यै॰ पुष्ट्यै॰ तुष्ट्यै॰ धनदायै॰
धनेश्वर्यै॰ भोगिन्यै॰ धात्र्यै॰ विधात्र्यै॰ कामदायै॰
कामरूपायै॰ उग्रायै॰ तेजोवत्यै॰ गौर्यै॰ जन्मा
यै॰ चंडिकायै॰ जगदंबिकायै॰ उग्ररूपिण्यै॰ भ
क्तवत्सलायै॰ उमायै॰ सरस्वत्यै॰ १०८॥ केशवादि
चतुर्विंशति नामभिः पूजयेत्॥ ॐ यत्पुरुषं॰ कर्दमेन॰
दशांगं गुग्गुलं धूपं चंदनागरुमिश्रितं॥ एतेषामुत्त
मं धूपं महादेव्यै निवेदयेत्॥ नमो देव्यै॰ श्रीविजया॰
धूपं स॰॥ ॐ ब्राह्मणो॰ आपस्रजं॰॥ घृतवर्तिस

न॰पू॰

१३ मायुक्तं महातेजोमयुज्वलं ॥ अज्ञानमंधकारं च नि॰
वारयतु मे सदा ॥ नमो देव्यै॰ श्रीविजयादु॰ दीपं स॰॥
ॐ चंद्रमामन॰ आर्द्रीयः के॰ सर्वभक्ष्यैश्च भोज्यै
श्च सर्वाज्य रससंयुतैः ॥ नानापक्वान्नकं देवी महा
लक्ष्मी नमोस्तुते ॥ नमो देव्यै॰ श्रीविजयादु॰ यथासो
पस्करमहानैवेद्यं स॰ अमृतोपस्तरणमसि ॥ अधा
यां प्राणे॰ शिवोम॰ ॐ प्राणायस्वा॰ ॐ अपानाय॰
ॐ व्यानाय॰ ॐ उदानाय॰ ॐ समानाय॰ ॐ ब्रह्मणे स्वा॰
मध्ये प्राश॰ पानी॰ ॐ स्वादुः पवस्व॰ पुनः प्राणायस्वा॰
ब्रह्मणे स्वा॰ मृगनाभि समायुक्तं कदली[illegible]रससं
युतं ॥ करोद्वर्तनकं देवी महालक्ष्मी नमोस्तुते ॥ श्री १३

चंपकैः चंच कल्हारैः शतपत्रैर्विनिर्मितैः ॥ पुष्पमालां प्रय
च्छामि गृहाण परमेश्वरि ॥ श्रीविज॰ वनमालार्थः
विजया॰ करोद्वर्तनं स॰ करवासनार्थे चंदनं स॰ पू
गीफलं मह॰ श्रीविज॰ तांबूलं स॰ हिरण्यगर्भेति
दक्षिणां स॰॥ इदं फलं मिति [illegible]॥ नारीकेरफलं
स॰॥ ॐ श्रिये जातः श्रिय॰ कर्पूरदीपं करुणा॰ श्रीवि
जया॰ महानीराजनदीपं कर्पूरदीपं स॰॥ ॐ नाभ्या
आसी॰ आर्द्रां पुष्करि॰ यानिकानि च॰ नमो दे॰ श्री
विज॰ प्रदक्षिणां ॥ ॐ सप्तास्यास॰ ताम आव॰ नमो
स्त्वनंताय॰ नमो देव्यै॰ ॐ आद्यालक्ष्म्यै॰ ॐ विद्याल
क्ष्म्यै॰ सौभाग्यल॰ ॐ अमृतल॰ ॐ कामल॰ ॐ
राजल॰ ॐ सत्यल॰ ॐ भोगल॰ ॐ योगल॰॥८॥
श्रीविजया॰ नमस्कारान् सम॰॥ ॐ यज्ञेन यज्ञ॰ यः शु

न·पू·
२४ चिःप्र॰ नमो देव्यै॰ श्रीविजया॰पुष्पांजलिंस॰ ॥ ॐ
नमोमहद्भ्यो॰ममनुनः॰ कथातेअ॰ यज्ञेन॰ ॐ
पराशुभ्रा॰ॐ रा॰आधि॰ सागासदडुति॥ श्रीविज
यादु॰ मंत्रपुष्पंस॰॥ आवाहनं॰ मंत्रहीनं॰ अप
राध॰ रूपंदेहि॰ लक्ष्मीरवत्प्रज्ञया नित्यं पूजनंप
कृतंमया॥ प्रसादंकुरुमे देवीत्राहिमांसिंहवाहि
नी॥ मंत्राक्षरमयेलक्ष्मीमातृणांरूपधारिणि॥
सर्वस्वरूपेसर्वेशे सर्वशक्तिसमन्विते॥ भये
भ्यस्त्राहिनो देवी दुर्गेदेविनमोस्तुते॥ दुर्गेस्मृ
ता॰ नमोदेव्यै॰ श्रीविजया॰ प्रार्थनांस॰॥ यस्य
स्मृत्वा च॰ अनेनपुर्षसूक्तेनश्रीसूक्तेनपो २४

राणोक्त मंत्रेणमू॰उमंत्रेणषोडशोपचारपूजनेनश्री
विजयादुर्गाबिंदुमाधवमहाविष्णुप्रमुखपंचाय
तनदेवताःप्रीयंतां॥ विघ्नमनो॰ बाणरावण॰ शक्ति
रू॰ गणेशांगा॰॥ सनकादिदेवतोभ्योनमः॥ सकृत्पू॰
गंधपुष्पंस॰ नैवेद्यार्थेअवशेषनैवेद्यंस॰ अनेनपूज
नेनसनकादयःप्रीयंतां॥ ७॥ अद्येत्यादि॰ श्रीवि
जयादु॰ प्री॰त्यर्थंब्राह्मणकुमारिकापूजांकरि
ष्ये॥ ब्राह्मणकुमारिकापूजांकृत्वा॥ एकोविष्णु॰
अनेनब्राह्मणकुमारिकाभोजनेनश्रीविज॰ प्री
यंतां॥ विसर्जनमंत्रः॰ ॐ उत्तिष्ठब्र॰ यांतुदेवगणा॰

न-पू.

१५ इदंपुस्तकंकानेटकरोपनामकआत्मारामभटस्यसु
तेबालकृष्णेनलिखितंगणपत्येइत्युपनामकशि
वरामस्यसुतेगोविंदरावस्यद त्तंस्वार्थंपरार्थंच

॥छ॥छ॥छ॥श्री॥श्री॥श्री॥छ॥छ॥छ॥

नवग्रहस्तोत्र समाप्त